वर्षे वर्षे तु या नारी कृष्णजन्माष्टमीव्रतम्॥
न करोति महापापा व्याली भवति कानने॥१॥
स्वसुरगृहनीवासी स्वर्गतुन्ध्योनरानाम्
पतिभवति [illegible] वेकी पंचमस्यदीनानी
[illegible] नमधुदधी [illegible] भामामाभे [illegible] बसंति
तदुपरिखरतुन्ध्यो मानाहिनोनरानाम्

उमसींचनवाँस्चन्द्रमार्दवालनभव ॥ मार्धम्नमनमयउ
गमनादवलस्थगं ॥ ॥ मामान्यां द्विविधं थाकं. पनं
वापवमेवच । इत्यादितिकवेकिमु. मलापवनथाचात ॥
पवतिन्नाउयाआतिः मेवापवनथाचागं । व्यापकल्ला
दर्धा तिमाः व्यापित्वादपनापिन ॥ भन्यानिलइवा
वृाकें विधानः पनिकीर्तितः ॥ उच्छिष्टं निष्कृतं

अद्येत्यादि अमुकगोत्रस्यामुकस्य. मम श्रीपरमेश्वरीदुर्गादे
वीप्रसन्नद्वारा मार्कण्डेयपुराणान्तर्गतसप्तशतीकारव्यदु
र्गामाहात्म्यप्रकाशकस्तोत्रपाठकरणप्रयुक्त देवीवाक्यो
क्त यथार्थसमस्तफलावाप्तिकामनासिद्ध्यर्थं श्रीपरमेश्व
रीत्रिशक्तिदेवतास्वरूपिणीदुर्गादेवीप्रीतये मार्कण्डेयपुरा
णान्तर्गतसप्तशतीकारव्यदुर्गामाहात्म्यप्रकाशकस्तवपाठ ब्राह्म
णद्वारा अहं करिष्ये. तदंगत्वेन ब्राह्मणवरणं चाहं करिष्ये.

मम्रात्वभोजातात्पकृतिचपलायांविषिवशानू ॥ सत्व
संवर्द्धव्यापवरगुणपूर्यापसविनीतथामंसंकव्यास्म
रहातलिलनानूदिवसं यथानयंहूतानांवजाहिन्दू
लाक्षहलगिका ॥ ॥

वपुःप्रादुर्भावादनुमितमिदं जन्मानिपुरा पुरारेनकापिक्ष्मपि
भवन्तंप्रणीतवान् ॥ नमन्मुक्तःसंप्रत्यहमतनुरग्रेप्यनतिवा
मिनीशक्षंतव्यंतदिदमपराधद्वयमपि ॥ ॥

ननयागकमावअननननसानि तकुलंक्षयना मकादाव
हवापिमकिगगरलनर्वपिनेताहृथोः कचिहृहिलिमाद
यकिंधनलीकेविलथागकुने थंयंवन्यतिनम्तनस्यपून
तीमाखूदिदीनम्वव ॥ दानिजावृडनाकावसनिममम्टहदुनी
मिर्वोममाना वन्चूवद्वोचयंगूजघनविनदिनोजानमोदःखुनो
कौ ॥ कुलुक्षद्वलगिन्यौसनपानिनदिनेसावलम्वमदोस किन्क
कानासदामत्यजेनहदर्पहहवानःलाकयू ॥ ॥ ॥
नि

॥ श्री ॥ देवदत्तो हरिं भजति ॥ भज धातोः प्रीत्यनुकूलव्यापारोऽर्थः ॥
प्रीतिरूपं फलं व्यापारस्य विशेषणम् ॥ तिपो वर्त्तमानत्वं एकत्वं क
र्त्तृत्वं चार्थः ॥ कालो धात्वर्थव्यापारविशेषणं ॥ संख्या तु आ
श्रयस्य विशेषणम् ॥ कर्त्तापि व्यापारविशेषणम् ॥ कर्त्ताऽऽख्या
तार्थभूतो देवदत्तादिभिरभेदेनान्वेति ॥ तथा चैकदेवदत्ताभिन्न
कर्त्तृकहरिकर्मकवर्त्तमानकालिकप्रीत्यनुकूलो व्यापार इ
ति बोधः ॥ आश्रयोपि ४

श्रीः २४

ॐ अथ गरुडोपनिषद् ॐ खगोत्तमाय विद्महे वैनतेया
य धीमहि । तन्नो तार्क्ष्यः प्रचोदयात् ॥ ॐ अस्य गरुडोप
निषन्महामंत्रस्य ब्रह्मऋषिर्गायत्री छन्दो गरुत्मा देवता
गं बीजं पं शक्तिः यं कीलकं सर्वविष प्रशमनार्थे ज
पे विनियोगः ॥ न्यासः ॐ गरुडात्मने अंगुष्ठाभ्यां न
मः ॥ ॐ वैनतेयाय तर्जनीभ्यां २ ॐ महानागाय मध्य
माभ्यां २ ॐ खगोत्तमाय अनामिकाभ्यां २ ॐ हूं दोम

पायकनिष्ठिकाभ्यां २ ॐ नागाय येकरतलकरपृ
ष्ठाभ्यां २ एवं हृदयादि: ॐ अनन्तकोचनसर्णश्रु
नामस्तुहिमवन्ने। कुंकुमारुणमाकंठात्केशान्नां चारुवि
ग्रहं॥ कणीशेरगरुडात्मानेसुवर्णसदृशप्रभं दीर्घबा
हुंवहस्तं धैं नागाभरणभूषितं॥ अनंतोवामकंटकं
ॐ स्यमत्रं च वासुकि:। तक्षक: कटिसूत्रं च हारं कर्को

टकस्तथा। पद्मोदाद्वाशाकर्णेतुमहापद्मस्तुवामत:॥
शंख: शिरप्रदेशेतु कुलिकस्तुभुजोत्तरे॥ विषंत्राणापु
स्तुलोव्यं पुभुनस्तु ॥ नत्रध्याने॥ ॐ योविश्व
प्राणहेतुरित्यादि:॥ एवं ध्यायेत्रिसंध्यायामात्मानं ना
दरूपिणं। सूर्यमण्डलसंकाशं सोममण्डलसंस्थितं।
पृथ्वीमण्डलमुद्रायावज्रोहं फट् स्वाहा॥ ॐ ॐ नमोभ

गवतेगरुडायविष्णोर्वरवाहनाय॰ त्रैलोक्यपरिपू
जिताय। ॐवज्रनखाय॰ वज्रतुण्डायवज्रपक्षाय॰
वज्रशरीरायवज्ररूपायविषहरणाय॰ एहिएहि
महागरुडायदुष्टनागानांछिंभि२ महाविषंछिं
भिं२ दुष्टमहादुष्टराक्षसांछिंभि२ आवेशय२ एहि
महागरुडकालकूटविषंमहाविषंनिर्विषंकुरु२

फट्स्वाहा॥ ॐनमोमहाविद्यांब्रह्मरुद्रनारदाय
वरहेनेन्द्रायइंद्रोभरद्वाजायभरद्वाजोवाचाय
जीवतिकामेभ्यःशिष्येभ्यःप्रयच्छत॥ ॐतर्कह्रीं
ॐत्र्यर्कॐह्रींॐत्र्यर्कह्रींॐविषहरणीविषरूपि
णीॐसर्पिणीहंतनिर्विषंविषंनष्टहतेइन्द्रस्यवज्रि
णःक्षिपःक्षिपःस्वाहा। ॐयदितानागिनोसर्प्पा

णां विषकानां भूतानां महाभूतानां प्रगोधानां गृहगो
धानां महामूषकानां· ॐ यद्यनंतकदुतेस्तं यदि नंतकः
स्वयं सचरति सचरति· ॐ यदि वावकीतटकदु स्वयं
सचरति सचरति। ॐ यदि पद्मकदूतस्तं यदि पद्म
कः स्वयं सचरति सचरति· ॐ यदि महापद्मकदुस्तं
तं यदि वा महापद्मकः स्वयं सचरति सचरति· ॐ य

दि वा महापद्मकदुस्नत यदि वा महापद्मकः स्वयं सचर
ति सचरति· ॐ यदि वा शंखपुलिकदूतस्तं यदि वा शंखपु
लिकः स्वयं सचरति सचरति· ॐ यद्देलापत्रकेदुतस्तं य
देलापत्रकः स्वयं सचरति सचरति· ॐ यदि वा कालिक
दूतस्तं यदि वा कालिकः स्वयं सचरति सचरति· अथ गा
यत्री· ॐ तत्पुरुषाय विद्महे विषहरणाय धीमहि। तंनः

शान्तिः प्रचोदयात् ॥ ॐ कँ जूँ ॐ सिपाहि स्वाहा ॥
ॐ ह्रीँ हूँ घरमां महाविद्याया मन्माया शंत्रा पठति गृ
गुयाङापि । यावज्जीविते नरनारी तावन्न दर्श
ति सर्पः ॐ ह्रौ व्यालरग्गा नरग्रा हयिवा विनन मो
सयति । जलेन मोसयति शतं व्यासरग्गा ग्राही क्षे
त्वा चक्षुषा मोक्षयति । सहस्रं व्यालरग्गा नरग्र ही त्वा

मनसा मोक्षयति ॥ प्रतिथिं पूजयेत् कन्या पुष्पा
लि विविधानि च । भोजनमन्नमेद द्यात् विषंगला
नि सम्पते ॥ इति हरिहरब्रह्मविरचिते गरुडोप
निषत्संपूर्णम ‒‒ शुभं भूयात सर्वदा ॥
स्वप्नवाराही मंत्र ॥ ॐ ह्रीं नमो वाराहि घोर स्वप्नं ठः ठः स्वाहा ॥

शक्तिर्लक्षणा व्यंजना च ।   स्वशक्यसंबन्धो लक्षणा ।

शाब्दबोधे वृत्त्या पदजन्यपदार्थोपस्थितौ कारणत्वं ॥

न्नयो विंशाश्च श्रीकाश्च· षोडशाक्षरजोम

नुः २३८०९५२३ सैवं द्विधाकृतो भागो विद्युन्ना

वर्षियोस्ति हा॥॰ उदारवृत्तार्थपदैर्मनोरमै

स्तदास्य रामस्य चकार कीर्तिमान्॥ समाक्षरैः

श्लोकवरैर्यशस्विनो· मुनिः स काव्यं शतको

टिसंमितं॥१॥

अथश्वेतवराहेत्यादि ॥ ॥अथादि ॥अमुकगोत्र

स्यामुकस्य सपरिवारकस्य सर्वबाधाप्रशमदुःस्वप्नानु

त्पत्तिदुःशकुनोत्थापद्भूस्यत्वदारिद्र्यानुत्पत्तीष्टवियोगा

नुत्पत्तिशत्रुदस्युराजशस्त्रानलतोयोद्भवजन्यामृत्याद्य

नुत्पत्तिमहामारीसमुद्भवाशेषोपसर्गोपशमनत्रिवि

धोत्पातोपशमनसदादुर्गासान्निध्यसर्वपापक्षयधन

धान्यसुतान्वितत्वयुद्धनिर्भयत्वसकलरिपुक्षयक॰
ल्याणोत्पत्तिसकलानन्ददाहगणग्रहपीडाशांतिदुः
स्वप्नसुप्नतोत्पत्तिभेविकरणाशिवोपद्रवनोत्तिक॰
वलहाग्निजगद्वशीकरणारोग्यशुभमतित्वसर्वसक
टनिवृत्तिसिंहदस्युवैरिदूरपलायनपूर्वकसर्ववि
धसौमनस्यप्राप्तिकामोमार्कण्डेयपुराणान्तर्गत

सावर्णिःसूर्यतनयइत्यारभ्यसावर्णिर्भवितामनु
रित्यन्तंब्राह्मणामुखद्वारायथासंख्यकाहत्तिदुर्गा
माहात्म्यपाठमहंकारयिष्ये ॥ इतिसंकल्पः ॐज
ज्ञाग्नतइतिपठेत् ॥ ॥वरणविधि॥ श्रीं ॥
ॐ धादेवीमधुकैत[illegible] म

समनकष्टनानारोग
आयुक्तिनाशहृदयखेदरोग
नकलहदुर्दशा.
दविशाधननामनकार्यसिद्धि
स्थनमित्रनाशनारोग
धाब्राह्मणदेवअर्थनाशसंशय

राजन्मअतिसारअभिचारभय.
द्विअर्थनाश.
तृध्यनपुत्रनाशसौख्य.
चप्राणसंदेहअभिचार
पंधनपुत्रहानि
षधनपुत्रस्त्रीलाभ
सनानारोगधनक्षय.
अधनपुत्रकार्यहानि
नकलहशोकनानावार्त्ता
दमध्यफलव्याधिवायु.
एसर्वसिद्धि.
धाअभिचाररोगराजभय.

केजन्मरोगविनाश.
द्विपुत्रार्थनिष्फल.
तृधनकिंचित्लाभ.
चरोगप्रवास.
पंकार्यनाश.
षतेजोवंतविशालाभ
सकष्टक्लेशरोग.
अनाशघातमृत्यु.
नशोकसंतापरोग.
दवुद्धिनाश.
एनानालाभ.
धाकष्टसंताप

१८साल
मितिजेष्ठबदि१मिखवहा
यालखमानथानविया
नकोरमोहनकासफं१
वाबाजकिफं:आखारभुद
फेरनका १मोहविया

व कुटुंबवृद्धि धनलाभ
वं लोकसर्वकलह कुटुंबनाश
ष सौभाग्यजयलाभमनःशुद्ध
स जननाश धनक्षय अशुभ
भ धनजनवस्त्रलाभपुत्रलाभ
न कार्यविद्याधनक्षय.
द शुभोदय
ए यशकीर्तिलक्ष्मीलाभ
श विद्याहानिमनसंताप

तृ जन्मस्थानहीनविद्याधननाश
द्वि धनवस्त्रलाभ
तृ चित्तकलेशशत्रुभयविवाद
च अर्थनाशबंधुचिंता
पं स्थानधनपुत्रलाभसंपद
ष चिंताकष्टधननाशशत्रुभय
स कार्यधनलाभस्त्रीसुखसिद्धि
अ शोकसंतापजीवसंशय.
न धनपुत्रलाभ
द कलहकष्टकिंचिद्हानि
ए पुत्रफलनाशलोकफल
द्वा धनपुत्रनाशस्त्रीवियोग.

सु जन्म धनपुत्रलाभमनहर्ष
द्वि पुत्रलाभमनहर्ष.
तृ धनपुत्रहानिकार्यनाश
च शत्रुनाशलक्ष्मीलाभ
पं धनलाभशत्रुनाश
ष रोगशोकापमान
स रोगशोकपुत्रनाश
अ धनपुत्रसुर्वस्त्रलाभ
न धनलाभसौख्यसंपद
द स्त्रीधननाशभयाल
ए मानलक्ष्मीवृद्धि
द्वा धनसौख्यसंपद

श जन्म अभिमानमृत्यु
द्वि कार्यनाशजीवसंशय
तृ धनपुत्रराज्यलाभ
च धनकार्यहानिअपमान
पं रोगकलहधनपुत्रनाश.
ष शत्रुनाशजनधनसंपद

श्रीगणेशायनमः॥ गोचर फल चित्तेकष्टं

आदित्यजन्मस्थितस्यफलम्‌ रोगहानि

द्वितीये ॥ धनहानि चित्तेकष्टं ॥

तृतीये ॥ धनलाभ स्थानलाभ

चतुर्थे धनं मानं च हीनं आलस्यं

पंचमे स्त्रीपुरुषयोर्मनारोगं

षष्ठे रोगशोकशत्रुनाश

सप्तमे पेकरोगमृत्यु

अष्टमे शत्रुवृद्धि विश्वासनाश

नवमे सर्वलोकविरोधरोग

दशमे स्त्रीधनसौख्यरोगनाश

एकादशे जयकार्यसिद्धिसंपद

द्वादशे कार्यक्षय अंगपीडा

चंद्रमाजन्म मनसौख्य कार्यसिद्धि

द्वि धनलाभ कार्यसिद्धि

तृ स्त्रीधनवस्त्रलाभ

च वाणिज्यअसिद्धि धननाश

पं कायरोगमध्यायुद्ध

ष रोगनाशधनवृद्धि

स वस्त्रलाभ वाणिज्यसिद्धि

अ प्राणसंदेहमृत्युरोगपीडा

न क्लेशकलहव्ययपीडा

द कर्मसिद्धि श्रीलक्ष्मीसंपद

ए आयुर्वृद्धि मनसौख्य

द्वा वस्त्राघातरोगधनहानिमृत्यु

अंगारजन्म राजपीडाकलहमृत्यु

द्वि अग्निचौरभयस्थानहानि

तृ धनलाभकार्यसिद्धि

च कलह धनरोग शस्त्रघात

पं सर्वांगे नानारोगोत्पत्ति

ष जनधनलाभ

स नीचभ्रमवादधनक्षय

अ शस्त्रघातमनहीन

न धनक्षयकलहनानाव्याधि

द आयुर्यशवृद्धि मनशोक

ए यशकीर्तिलक्ष्मीलाभ

द्वादशे नीचरोगसंताप

बुधजन्म वस्त्रबंधनबुद्धिनाश

द्वि धनलाभ मनहर्षवाक

तृ मित्रसज्जननाश

रागा॥का॥सावना॥मलन
व्रजमहाविहा॥निनन्दको
नन्दनसाबना॥ध्रु॥बाज
नतालमृदंगसारंगराल
कध्मननकिओनि॥ध्रु॥
अगरतुलाफूकुमकूमक
मन॰ कनककृवनिओनि:
ललना॥उकस्वरकनव
लनागनलालनकबाया
नि॰ नन्द॥२॥ ॥ ॥

राग॥काफि॥जवमूना
तिकधुनिसुनिकाकपनें

हाउयानाब[illegible]सलयिआदि
घनि॰ जव॥ध्रु॥हनओनहि२
नाहिमाने॥उनकोसुनकी
लयिजुध्विकाजनि॰ हांजि
॥१॥साहसनरूपियाउ
मबदूनायक बोलकूके
पायापनि॰ हां॥२॥नन्द
महनकोकूवेनकोद्वीया॰
धूदताऊननागमनिसा
गनि॥३॥ ॥ ॥नागका॥
ॐमनागनभिनिकोवानन
संलागिहानहाना॥ध्रु॥हां
वननअमयन[illegible]नन[illegible]रये

क्लोचनेहारिणगर्वमोचने माविन्नूबयकृशांतिकृणात्वैः।
उद्ध्रषयदिजीवहारकः सायकोमरत्ने नलिप्यते ॥८

कु	रो	म	आ	पु	ष	अ	म	पू	उ	ह	चि	खा	गि	अ
अ	ओ	गे	कु	के	रु	डि	म	मो	टे	पू	पे	रु	ति	न
इ	व	वो	घ	को	हे	डु	मि	ट	टो	ब	पो	रे	तु	नि
उ	वि	क	ङ	ह	हो	ढे	मु	टि	प	न	र	रो	ते	तु
ए	बु	कि	छ	हि	ड	डो	मे	टु	पि	ठ	रि	त	तो	ने

जे	म्र	घ	उ	अ	भ्र	ध	त्रा	घ	उ	रे	अ	भ
मो	ये	भु	भे	त्र	खि	ग	गो	से	दु	दे	चु	लि
य	यो	ध	मो	जे	खु	गि	स	सो	ठ	दो	चे	लु
यि	न	फ	ज	जो	खे	गु	सि	द	झ	च	चो	ले
यु	नि	ढ	जि	ख	खो	गे	सु	दि	श	चि	ल	लो

कलाकार्तिक

अथदन्तधावननमाह॥ विष्णुः॥ प्रतिपद्दर्शेषष्ठीचचतुर्दश्य
ष्टमीषुच॥ नवम्यांभानुवारेणदन्तकाष्ठंविवर्जयेत्॥ ना
रदः॥ चतुर्दश्यष्टमीपौर्णमासीसंक्रमणेषुच॥ नंदोमु
खनवम्यांचदन्तकाष्ठंविवर्जयेत्॥ श्राद्धेपक्षेचनिय
मेतथाप्रोषितभर्तृका॥ व्यतीपातेचसंक्रान्त्यानन्दाभूता
ष्टपद्वीसु॥ तैलक्षौरंरतिंमांसंदन्तकाष्ठंचवर्जयेत्॥ ॥
वशिष्ठः॥ शन्यर्कशुक्रवारेषुकुजाहेव्रतवासरे॥ जन्मा
हे श्राद्धदिवसेदन्तकाष्ठंविवर्जयेत्॥ स्कान्दे॥ अत्यंगे

उत्तेधिस्नानेदन्तधावनमैथुने॥ जातेचानिधनेचैवतत्
त्कालव्यापिनीतिथिः॥ व्यासः॥ अलाभेदन्तकाष्ठानांनि
षिद्धायांतथातिथौ॥ अपांद्वादशगण्डूषैर्विदध्याद्दन्तधा
वनं॥ इतिवचनात्॥

श्रीगणेशाय नमः॥

लट् — भवति — वर्त्तमाने
लिट् — बभूव — परोक्षे
लुट् — भविता — भविष्यदनद्यतने
लृट् — भविष्यति — भविष्यार्थे
लोट् — भवतु — प्रेरणाशिषि
लङ् — अभवत — अनद्यतनभूते
विधौ लिङ् — भवेत — विधौ
लुङ् — अभूत — केवलभूते
लृङ् — अभविष्यत — हेतुहेतु
लिङाशिषि — भूयात

दाहत्वावछिन्नं प्रति मणाभावविशिष्टवह्नित्वावछेदकाव
छिन्नवह्नेः कारणत्वम् १ दाहत्वावछिन्नं प्रति उत्ते
जकाभावविशिष्टमण्याद्यभावविशिष्टवह्नित्वावछे
दकावछिन्नवह्नेः कारणत्वम् २

कारणगुणाः कार्यगुणानारभंते इति नियमः ॥
यथा कार्यताकारणताबालासा किं चिद्धर्मावछिन्ना कार्यता[illegible]त्वा
कारणतात्वात् घटनिष्ठकार्यतावत् दण्डनिष्ठकारणतावत्

यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणं
जेवसहितस्य रजेदत्वादात्मम

ॐ नमः श्रीकृष्णाय ॥ बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालां । रंध्रान्वेणो
रधरसुधया पूरयन् गोपवृन्दैः वृन्दारण्यं स्वपदरमणं
प्राविशद्गीतकीर्त्तिः ॥ ॥श्रीमन्मुकुन्दाच्युतमासदा ब्यात
कौमारं पंचमाब्दान्तं पौगंडं दशमावधिं । कैशोरमापंचद
शात् यौवनं तु ततः परं ॥ ॥महाभागवतटीकायां ॥

वर्त्तमानकारिका याक्रिपातद्भावको यो च भूतमात्र

ग्न्यादेशप्रत्यययोः ॥ इणः कुम्भ्यां परस्यापदान्तस्यादेशः
प्रत्ययावयवश्चयः सत्सम्मूर्द्धन्यादेशः ॥ इणःद्वि रंतस्य
सम्पूतादेश एव षः ॥

१ल्लसत्रायाँ ॥ लिं
अनूवल्लव ॥
अनूवल्लवाम ॥
अनूवल्लविम ॥

१ल्लसत्रायाँ ॥ लुं
अनूलविता ॥
अनूलवितारौ ॥
अनूलवितारः४ ॥

१ल्लसत्रायाँ ॥ लं
अनूलविष्यति ॥
अनूलविष्यतः ॥
अनूलविष्यन्ति ॥

१ल्लसत्रायाँ ॥ लं
अनूलवि ॥
१नूलविषाति ॥
१नूलविषत ॥
१नूलविष्ठा४ ॥
१नूलविषाम्याँ ॥

१ल्लसत्रायाँ ॥
अनूलविषीष्ठ ॥
अनूला[illegible]विषीयास्तां ॥
अनूलविषीनन् ॥

पूर्णपिण्डत्वा लवदीयकीर्त्तिं कर्त्तुं वल्फोन हि
वद्धमि। नयाहिंवादं पवित्रितनुं को मा स माग
तार्ह नवदर्शनाय ॥ ॥ ॥
ॐ नमः सचनोरिरं चुरुं रुरु हु हुस्वाहा॥ धुलोसातवेरमंत्रीख्युलोदुला
मित्रपालजनमुसातलागपति· मम कोमेत्र:॥ शुभम ॥::::::

१ श्रीजगन्नाथाय ॥ ॥कदाचित्कालिन्दी
तटविपिनसंगीतकवरो, मुदागोपीनारीवदन
कमलास्वादमधुपः रमाशंभुब्रह्मामरपतिग
णेशार्चितपदौ ॥जगं॥ महाम्भोधेस्तीरे कनक
रुचिरे नीलशिखरे वसन्प्रासादान्तः सहजबलभद्रे
ण बलिना सो सुभद्रामध्यस्थःसकलसुरसेवावसर
पदौ ॥जगं॥ भुजे सव्ये वेणुं शिरसि शिखिपुच्छं क
टितटे, दुकूलं नेत्रान्ते सह[illegible]कटाक्षं
विधत्ते। सदाश्रीमद्वृन्दावनवसतिलीलापरिचया
॥जगं॥ रथारूढो गच्छन्पथि मिलितभूदेवपटलैः स्तु
तिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः। दयासिन्धुर्ब
न्धुः सकलजगतां सिन्धुसुतया ॥जगं॥ कृपापारावा
रः सजलजलदश्रेणिरुचिरो, रमावाणीरामः स्फुर
दमलपङ्केरुहमुखः। सुरेन्द्रैराराध्यः श्रुतिगणशि
खागीतचरितो ।जगं॥ परब्रह्मापीडः कुवलयदलो
त्फुल्लनयनो निवासी नीलाद्रौ निहितचरणोऽनन्तशि
रसि ।रसानन्दो राधासरसवपुरालिङ्गनसुखो ॥ज
गं॥ न वै याचे राज्यं न च कनकमा[illegible] विभवं
न याचेऽहं रम्यां सकलजनकाम्यां वरवधूं। सदाकाले
काले प्रमथपतिना गीतचरितो ॥जगं॥ हरत्वं संसारं द्रु
ततरमसारं सुरपते हरत्वं पापानां विततिमपरां याद
वपते। अहो दीने नाथे निहितचरणो निश्चितमिदं॥
जगं॥ ८॥ जगन्नाथाष्टकं नित्यं, यः पठेद्भक्तिमानवा
:॥ वैकुण्ठभुवनं याति सर्वसत्यं वदाम्यहं॥ ॥इतिज
गंकनाथाया

अद्येत्यादि॥ ॥अमुकगोत्रस्य अमुकस्य: मम श्रीपरमेश्वरप्र
शंनद्वारा सप्तजन्मार्जितकायवाङ्मनोजनितज्ञानाज्ञानकृत
सकलपापक्षयादित्यादिग्रहाणां महदशानां योगिनीद
शान्तर्दशायामरिष्टशान्ति भूतप्रेतादिदोषप्रशमनापि
नृपायुथिताकालमृत्युमही रोगभयरुटिति निवारणा
र्थमिहत्रसुखभोगायुरैश्वर्यप्राप्तिकामपरत्रमोक्षा
र्थं श्री इश्वरसुप्रीतियथावृत्ति संख्यापरिमित श्री अमु
कभट्टारकाया छिन्नजलधारया षडंगरुद्राभिषेकं ब्रा

ह्मणद्वारा अहं करिष्ये॥ तदंगत्वेन ब्राह्मणवरणं चाहं
करिष्ये॥

सं८२१ पौष वदि ३० मितिस चतुर्दशीया लाय
यातवन्दोवस्तयाना मेसा लायाङोवा हि क
मुल्लो यात जल.नू.नू कं नलाय याग्रु ल ल्लोय
यकेका पशुदाम नकार॥ वेवा वन्दो वस्त जल
लोयति ग्रु का चायाक वोल. पिरवहा

१लसमञायाँ॥ लऽ नवति॥ नवन४॥ नवकि॥	१लमञायाँ॥ (श्रोगविन्यर्थ॥ नविता॥ लूऽ नविगे॥ नविन४॥
१लसमञायाँ॥ लऽ नावकर्म्म॥ लयम॥ लयेने॥ लयन्ने॥	१लसमञायाँ॥ लऽ नविष्यति॥ नविष्यन४॥ नविष्यकि॥
१लसमञायाँ॥ लिऽ यनाऽ॥ वलव॥ वलवउ४॥ वलवू४॥	१लसमञायाँ॥ लऽ भूनविष्यनु॥ भूनविष्यनी॥ भूनविष्यन॥
भ्रालिबि॥ लूऽ लयानू॥ लयाक्रौं॥ लयासू४॥	१लसमञायाँ॥ लऽ भूलनु॥ भूलनी॥ भूलवनू॥ भूल४॥ भूलनी॥

१लटू — तिपू १८ भ्रालोकसमदक्रमंवकलिनानन्नामनाथ्यातिर्न
१लिकू — यानू १९ स्वर्गप्रायमइगंमवसमहाकालीकमथासय०॥
१लीटू — उयू १८ नगसीवइवालकाविनेहलकाप्रनानालकाद्रि
१लटू — दियू १८ ऊविगमयक्रकलेकिहलेमकेअरनत्कान्छके४॥
१लिटू — लयू १८ स्वयमत्रकनमगेव लामहविअरकन्छक०सम:
१लीटू — ~~भ्रालिबियानूत१८~~ ह०योन४॥
१लूकू — भ्रालिबियानी१८
१लूटू — ना१८

झलर.डिया सुरखा
ति.जवे. मः नाला
रूपारागविग राग ।।

[illegible]

श्रीगणेशायनमः॥